
कविकुलगुरु - कालिदास - संस्कृत - विश्वविद्यालयः

श्री

१

श्रीगणेशायनमः ॥ संसारेवासस्सिध्यर्थं नत्वा वीरंजि
नेश्वरं ॥ आसाभासधनेमुले पासकेरत्तिवोच्यते ॥
अमंतछुतरापाचितव्याधारसैजेदेसे श्रीसूपितिस्वा
मउत्पन्नो मुनिराजसुतः श्रीमंतराजउचेराभाषितं
लोकानां ज्ञानार्थं ॥ अतीतानागतंवर्तमानंज्योतिः
शास्त्रभाषितेवार्दपूर्वसंस्थराय ॥ अवयद ॥ १ ॥ इत्य
क्षरचतुष्टयं पासकपार्श्वेलिखितव्यं ॥ ततः पासक
महस्तेगृहीत्वा यात्किंचित भूतभविष्यंवर्तमानंतत्स

१

र्वं मनसिअवधार्य ॥ देवतामिमंत्रेणपासकं स्पृशामि मंत्रि
तं कृत्वा प्रकारस्य चिंतेनयासकंधारत्रयंपातयितव्यं ॥ चिं
तितंकार्यस्य फलाफलप्राप्तिर्भवति ॥ अथ पासकमंत्र ॥
ॐ विद्रुस्विधाहि अमपरिरखगविजिलि अमहाविस्सिभागो
गुरायंदिरैस्वाहा ॥ इतिमंत्राक्षर ॥ ७ ॥ अअअ ॥ १ ॥ भो
छ्रवतंवाधलमेसमास्तिरूपतांसंतुवकुलत्वं ॥ तवस
हृदयोभवतु ॥ स्वदर्पंचितविष्यसि ॥ वयास्तत्त्वि
तितंतंकार्यंसिध्यातिनात्रसंदेहः ॥ अददा ॥ २ ॥ भोए

ह्रक त्वं स्वस्त्यस्तु त्वया चिंतितमेतत्कार्यं न सिध्यति ॥ तत्र प्रयं
त्वं मा कुरु ते चापि बलमेव नास्ति ॥ अधुना एतत्कार्यंम
धुना लप्रिय ॥ यष्यामधु जालं मादिकां वेष्टियति ॥ त
या एतत्कार्यं सत्तु वेष्टितं वर्तते ॥ बलं कर्तुं न प्राप्नोषि ॥
तत्र चापि कश्चिदुपायश्चिंत्यते तत्रोपाये ह्वर्भयम
भिष्य सा प्रविष्यासि ॥ तत्रस्तत्कार्यं सिध्यत्येव ना
त्र संदेहः ॥ ॥ अथ पद ॥ २ ॥ भो पदकवस्त्वम् एतत्कार्यं

शी०

ते॥ तत्रगते सति तव अर्थलाभो नास्ति॥ कार्यसिद्धि र्वतन्भवति॥ अतस्त्वं गमनं माकुरु॥ ५॥ अदब॥ भो पृच्छक स्त्वया यत्र प्रयोजनं चिंतितं तस्मिंस्तत्र सिद्धिर्नैव भविष्यति॥ भवतां तत्प्रयोजनं स्थैर्यं भविष्यति॥ ततः परे पदे तव सत्वरास्तु मा सा भविष्यति सर्व सिद्धिर्भविष्यति॥ एवं वनतबोपारि अभयं चिंतयति तैः महप्रीतिं माकुरु॥ ६॥ अथत्र॥ भो पृच्छक त्वया चिंतितं प्रयोजनं वित्समं भवति त्वया वंधनासह विवादं संचयंति तव बंधुरथ भुनातवो परिसतु लंगतो लि॥

२

मयासोत्रतुल्यंसासिष्याति ।। स्तलत्वार्यसिंहपराक्र
मतुल्यं ।। अत एव तया जेतुं न सक्यते ।। अन्यच्च यत्विं
चित्वार्यमनासिचिंतयिष्यसि तस्य कार्यस्य भङ्गं नह
स्यते ।। अत्र दैवं समर्पणं नान्यत ।। अपद ।।४।। भोष्ठ
च त्वदीयं प्रये जनं प्रभूतकालेन दैवं यस्तान्महाप
छे न सिध्याति ।। यत्किंचित्कार्यमधुनाममसिचिंतयि
ष्यासि तदपि नासिध्याति ।। अत एव आग्रहं मा कुरु अ
न्य द्वंत्र भुमातप्रयेचि … चरणौ विरुद्धं चिंतयाति ।।
तस्योपसांतिर्भविष्याति ।। किंच ततः कुतोपिमनं हस्य

त्वमेवज्ञात्वासि इदानीं सगरवानोमघसत्रुघ्नवनेनप्रभ
तेमानमाकुरु तवविषमे भूते पथा अर्पणाभिरावह
त्तेनसत्रुरागानेनसह सर्वप्रकारेनकार्य त्वासिध्या
ति ॥६ अथच ॥ रमयतां सेयं छकत्वदीपं प्रयोजनं
विहितं ॥ अधुना तव चित्ते किंचिद्याकुलत्वं चासिन ॥
तत्परित्यज्यं स्वचित्तोऽ स्य त्वदीयो वंधुस्ताभ
वृद्धि दास्याति ॥ विकल्पं परित्यज्य तास्वराज्यपूर्वं त्वया
वंधुवचनं कृतं ॥ अथ त्वदीयो नेपथ्यासतासो

③

श्री०

५

गतः इदानीं धैर्यं धृत्वा नैरीयसि चेत ॥ ततः कार्यं
सिद्धिर्भविष्यति नान्यथा ८ च प्रदस्या ॥ भो उष्ट्रक
त्वं स्मरसु यत्किंचित्प्रयोजनं त्वया ब्रूति तेन ऽभ्द्रे दृष्य
ते ॥ यत्वं चित्त स्वबुध्या वदे । कृ दीर्घोऽसि ॥ तु
नः स्तत्वा यं दीर्घ मापृत ॥ करि ति कृते सति कार्यं
सिद्धिर्भविष्यति विलंबे सति कार्यं न भविष्यति त्वं
स्वबुद्धया चिंतय मा कुरु ॥ इदानीं तव दिवसाः सुखा दृ
श्यंते ॥ ततः सिद्धेन कार्यं कुरु ॥ तेनोक्तं यत्किंचि

तो भविष्यति॥ तुभ्यं आपसंपत्तिर्मनस्तुष्टिश्च॥ भवि
ष्यति ८ अश्व॥ भो हंस त्वं स्फुरत्व सर्वप्रकारेन वि
लंबचिंतोसि॥ परं त्वया विलंबचिंतो मा भव॥ त्व
वउद्यमपरो भव॥ उच्चैर्मंत्रं स्फुट दुर्विधीन विघये आ
न रक्षं कुरु॥ संसारे एक धात्र भावेन सुभा तुभ्यं स्तुयो
भवति॥ तत्र सुख सुभोहर्षविषादिनं मा कुरु॥ विषा
दं मा कुरु॥ सदैव सुखमयो भव॥ अस्मि॥ प्रेषयाने
…अं पत्नी चिंता विपतेत त्र परित्या मं कुरु॥
तेन प्रथमेन स्तु…रं तव प्रयोजनेनेन हेन भविता व्यंना

५

चसंदेहः १० अथप्र० ॥ गौ० छकतवचिंतितं अुस्विरंना
नाविकं मेरूपंप्रवर्तते ॥ तय ॥ यल्लवोजनंचीतितं रू
नंविवतरं ॥ यदिभृत्तिसयेन आप्रातंधरिष्यासिसद्दाये
हावकं ॥ विष्याति ॥ तवाभीं चलयोपरिसचवोविरूढं
चिंतयति ॥ महत्पुण्यमेकं क्रियमानेसातितपारिवलका
पेस्यनिर्वाहनेप्राप्नोति ॥ अत्रैवंसमर्थनसन्मतेः ॥ ११ ॥
अथप्र० ॥ गौ० छकं अथधारय अधुना त्वदीयं चिंति
तंपूर्वंनास्तिस्थाभुत्वंवततैलानिपत्रतोपेकस्विद्धर्म ॥ ५
क्रियतेतेनधर्मेनपुनरपितवचिंतितंसफलंभविष्य

तिविरुद्धविनाशः सर्वसौख्यलोभः आत्मिसिद्धि रूपभावि
ष्यति ॥ स्वयरस्य रद्रव्यानोलाभो भविष्यति ॥ अतर
व धर्मपर नम्यं कुरु ॥ १२ ॥ अथय ॥ ओम् पृच्छकयत्त्वं चि
चित्तेनाचिंतयमसि [illegible] पसि च्यती त्याते कृयसितत्था
यैभम ध्यानानियमेन भविष्यति ॥ अत एव स्थिरचित्तो
भव धाडुलत्वं त्यज ॥ प्रयेतव संपत्तिर्धान्य पुत्रागत
इदानींतव चित्ते पुरुष सहस्रवां छनैया नियमेन भवि
ष्यति नात्र संदेहः ॥ १३ ॥ अथ च ॥ ओम् पृच्छकस्य यत् चिंत
ति कार्यस्य प्राप्तिर्भविष्यति मन्त्रोसत्पो प्राप्तो हृद्यं मति
र्लभ भविष्यति ॥ यदा तदा भेदं मा कुरु धैर्यं धुरन्धरेण

श्री०

६

व कार्यं सिध्यति नात्र संदेहः यथा यथ गलितं वो भवति तथा तथ ॥ सत्तुन सोभाविष्यति कार्यं च सिध्यति निश्चितं ॥ १४ ॥ अस्य ॥ भो पृच्छक अप्रवचाने कुरु त्वया चिंतितं कार्यं सहायेन विना न भवति ॥ यथा अरुणा सोहकः पुरुषो अस्व विना गुप्त्वं पतुं न समर्थो भवति ॥ तस्य दृष्टांतं स्पष्टार्थं महता कष्टेन दुःखेन वा सह धर्मेन सिध्यति सहायेन धरित्वा ते सिध्याति त्वं न नात्र संदेहः ॥ १५ ॥ अवअ ॥ भो पृच्छक अवधारनं कुरु त्वया चिंतितं तं कार्यं त्वया कर्तुं न सकते न हति काले न तेपि च धैर्यं भ्रातं पृच्छ यातु भविष्यति ॥ इदानीं तव मनोजनं भद्रं वै पुजनाः करिष्यति ॥ ते न वं पु

जनेन हृत्वागतव प्रयोजनं सिध्यत्येव नात्र संदेहः॥ २६॥ अ
थ॥ भोः पृच्छक स्मर त्वया चिंतितं प्रयोजनं त्वरितं सिध्य
ति यदि सिध्यइति इष्ट देवतायाः पूजां क्रियते तदा सा देव
ता तव कार्यं करिष्यति तत्प्रसादात्सर्वोपद्रवा दूरीभविष्यंति॥
अन्यच्च यत्प्रयोजनं त्वया चिंतितं दुस्साध्येन लाभं न सिध्यति स्मर
तावच्छन न सिध्यति॥ कामाद्विविधं प्रकारैः तन्नोक्तान्युपक्रियाः
सिध्यति दीर्घकालेन यासिध्यति॥ तत्प्रयोजने नैव समर्थम्
न भवितव्यं त्वया॥ २७॥ २६॥ इतिश्रीप्रश्नकरणे॥ अथ॥ भो
पृच्छक स्मर त्वया चिंतितागमनस्वरूपं कार्यं भवति कार्यं सि
ध्यतीति तवसंतोषो भविष्यति अनेन कार्येण तव महा

भक्त्यानंदे यो धियाति सर्वं विकसितार्था नो माननिर्भिं यशेन नात्र
संदेहः ॥१॥ ववक्षा ॥ भो पक्षे स्व गुरुत्वया चिंतितं यत्तस्मिन्
कार्ये तव सिद्धिर्हस्तगतो परं तेषां नापि सहविश्वासं मा कुरु ॥
तवोपरि तव सत्रवो विरुद्धं चिंतयंति स्वयं भाग्यतो जयसि
तवाग्रे अनेकधा स्तुतिः कुर्वंतितैः सत्रुभिः सहविश्वासं
मा कुरु यदि पुत्रापि गंतुमस्ति तर्हि गच्छ तत्र ते सति कार्यसि
द्धिर्नात्र संदेहः ॥२॥ ववय ॥ भो पृच्छक स्व गुरुत्व कीयामिम
तं कार्यं साधय अस्वारय यदि त्वं गमनं वांछसि तर्हि त्व ॥
स्वपत्स्यति वांछसि ॥ तर्हि तिष्ठ उभयोरपि पक्षयोरुपरि
भो सिद्धं तत्कालं विहाय ॥ अन्यस्य कार्यस्य सिद्धिर्न हस्त

श्री०

२

पुविरुध्धं चिंतयति त्वं वस्वकीयं स्वभावं न त्यजसि स्वचि
त्तेषे दंभ हसि किं चेत्वया पुर्वं षकृतं दुःखादिकमनुभूतं ॥
त्माधुनातव यत्पुन्यं किंचित् दृस्यते तेन पुन्येन भूत्वा त
वसर्वं सिद्धं भविष्यति नात्र संदेहः ॥ २३ ॥ वरदृष्ट ॥ भो
पृछक पुष्पाभस्त्वं चिंतयसि गमनं तव भवति सा ति ॥ अवि
रोध्येन मार्गादि तो लाभो भविष्यति किंचम ध्येरोगादिकं ॥
दृस्यते तदपि उपसम्यति अन्यत्र किंचित्तव कार्यं करिष्य
पुरुषो नास्ति यत्तत्र षेदं मा कुरु तदपि पुनरापि का
र्यं समीचीनं भविष्यति संप्रति तव सुष्मादिकं दृस्यते ॥

२

ष्यति ॥ अमित्रमपि मित्रत्वं यास्यति तत्र सर्वं कार्यं अनाया
सेन भविष्यति निश्चितं ॥ २१ ॥ वचन ॥ भो पुछ श्रु सम्यक् प्र
बोधस्य यस्तत्प्रयोजनं महता प्रयासेन चिंतयसि तत्पापि
नासिध्यति यदि सिध्यति तदा स्वोपायेन दीर्घकाले महता स
हायेन वा यथा निछिद्रनौकेन सहायं विना समुद्रस्य पारं गं
तुं न शक्यते ॥ तारसमेतत्कार्यं च सर्वमस सहायं विना न भवि
ष्यति ॥ भो पुछ श्रु पुत्रवचनात् हृत्पुरुष सखा सात्विक विदुर
हस्पते ॥ तर्हि त्वां प्रतं तत्र सर्वं भार्यं सिध्यत्येव निश्चितं ॥
२२ ॥ वचय ॥ श्रूयतां भो पुछ वचनात् उनल वो परितव व

तेतत्रागहनंमा।उरु क्रियमंकार्यंनासिद्धपति चेतसि।याल्म
नं सर्वे।हृदसंसोच यित्वाविषादमा।कुरु।। अनेनैवविष
येनकार्येनभावितव्यं।।इत्याग्रहस्तवचेद्धितस्यकार्यस्य
सिद्धिंकरिष्यतिनिश्चयेननात्रसंदेहः।।१८।। वदद।। औ
पच्छक अवगम्यतां। तत् श्रुणु त्वयि आचिंत्यमानं कार्यं नष्ट
कार्यं विवसां प्रतनासिध्यति यथास्य तस्य पुरुषस्य औ
षधं नासिध्यति।। तथास्तत्कार्यं नासिध्यति।। असा
ध्यं।। अस्वास्ये षु पुरूषे षु विस्वासं करोषि ते वसांप्रतं
तवमानसि पहकाः प्रतिभासते।। परोक्षेतवो परि विरुद्धं
वि २

श्री०

८

चिंतयति ॥ ततश्चाग्निरूद्धेषु पुरुषेषु सत्सु त्वदीयं कार्यं भ
द्रं न सिध्यति ॥ परंतु ते सत्वेव रूव भविष्यति अतियदा दिनेषु
गतेषु सत्सु तत्कार्यं सिध्यते ॥ २० ॥ वयव ॥ भोः पृच्छक प्रतिय
चं भो भुजनालव चितसे चे संसत्वं विपत्तो चित्तस्य चं चलत्वं प
रप्रवा यत्र चिंतो सा ति तत्कार्यं सिध्यति रघा कारनं चिंत
छेदमा धुरून् ॥ सा प्राप्तिस्तव यस्मो न अस्ति यस्मात् पश्चात् रंभरोचि
तवोपरि दुःसमुन्म वंचरोतिमि त्रमपीहसमु भवतितत्रवि
यासमा कुरू ॥ ततः सर्वं मस्तु मंचर्मता: फ्युं ये इतः परंतव पुन्या
दयोस्ति अत्र वद्धमविष्यति बंधुः आवि स्या सीवि स्वा संवरि

८

अतस्एव सर्वं कार्यं सिध्यति संतोषो भविष्यति नात्र संदेहः॥
२४॥ चय ३॥ ओष्ठ छुक स्पर्शितो ऽत्र यस्तु यतो ऽपूर्वविश्रुति
तं कार्यं हुः स्व साध्यं त्वमतो वस्त्रिपिलो पिं कस्यापि विस्य
संमानुस्वकिं चजो ववितं विता यसंप्रतंतवं वंधा द्यस्त
वोपरि सतुल्यमाप्तः संतितद्युयसा त्यपि देवगुरूपूजांपुरः॥
स्वं प्राते सा तितव सर्व वांछितार्थसिद्धिर्भविष्यति नात्र संदे
हः॥ २५॥ चत्रय॥ ओष्ठ छुकं पश्चिमितं त्वया तद्य वगछसो
प्रतं त्वदीयचिंतं स्मपत्र गंतुसं लग्न पास्ति तत्र गते सा ति फ
लप्राप्तिर्भविष्यति त्वमहांतं ज्ञानं दास्यामि छेमेन सर्वं धो

(१)

श्री०

१०

छितंसा ध्व यसि भ्रम पंक्र यन्नासे भविष्यति एतस्मिन्स
मयेतव भाग्यमस्ति धैर्यं कृत्वा सर्वसाध्यं भविति नात्र सं
देह: ॥१६॥ वयम् ॥ भोपृच्छक त्वं श्रवधारन्तं कुरु एतास्मि
न्त्वया चिंतितं कार्यं सिद्धिरस्ति ॥ अपतस्मिन्स्थे सोपि
हस्तेल्केश से ऊनसभ्रातेबंधु सहा यवलेनल्केसो गमि
ष्यति श्रत: अवस्यमेव कार्यं सिध्यति नात्र संदेह: ॥१७॥
वत्राव ॥ भोपृच्छक त्वया चिंतितमवधार्यतां त्वया चिं
तितकार्यं सउत्कृष्टेनासिध्यति परंतु कष्टं प्राया स्सश्चम
विष्यति यद्यपि महता आयहेन कार्यं करिष्यसि तदा

१०

कार्यं नास्स्मृत्यं युते अतस्त्वत् त्वतत्कार्यं परित्यज्य ॥ अन्य
त्कार्यं चिंतयं द्वैर्पेय [illegible] मा कुरु ॥ अन्यस्मिन् चिंतिते कार्ये
सिद्धिरस्ति ॥ २१ ॥ वदध ॥ भोः पृच्छक यत्त्वयास्मिन् शकुने त्वया पत
त्वया चिंतितं कार्यमतीव गहनं महत्तरं कष्टं नापि सिध्यति ॥
अतस्तत्रापि अभिलाषं त्यज यत्पापीयो मयानुभवम
रूपं [illegible] समुद्रस्य पारं गंतुमभिलषति तत्का
र्यं तेन अवगम्यते तत्सदृशमिदं कार्यं ॥ अपवादैवं
सालपमपि भूत्वा सिध्यति चेत्तदा तव महद्वैसो
भविष्यति नात्र संदेहः ॥ २२ ॥ वक्ष्य ॥ भोः पृच्छक आ

(18)

भार्य वचनत्वया यत्र्चिंतितं कार्यं तादृश मत रन्स्ते ष्याति॥
यथा जलचरेज वो जलान्निर्गतः सन्नेमीयति तस्येदं कार्यं
त्वे सवहुलंभ्यति अत्र कार्ये त्वदीयास्तत्र पोपकत्वः प्रति
ठेचक्राः दृश्यंते॥ किं रात्रुवा पैसि ष्याति तरयमुना युः
त्वया कस्त्विद्धर्मः क्रियते तेन धर्मेण तेना चिरेकाले नैव
त्वत्कार्यं त्वरितं सिध्याति नात्र संदेहः॥ ३०॥ वेपद॥ मो
प छक स्रूयतां यथा स्थितं यया म्यहंत्वया चिंतितं का
र्यं त्वरितं नै वसिष्याति त्वं दृढचित्तो भवाति॥ यो मा कु
रु दुष्कानां प्रवेसनमव काशं चया दीके यथा प्रभुं दुष्कानां

॥४६॥ तृतीयप्रकरणं॥ ४७॥ भोः फक्कुक यत्कार्यं तत्वमीकु
सितं कुरु तेऽरम्भये अनन्तं नह ड मपरो भव॥ त्वया स्वकार्ति
नान्त्वार्येन सा यतेऽर्थेन चित्तु कुरुष सहाये न तत्कु यै
तुष्टिस्त्यति॥ यथा अपुत्रस्य पुत्रो त्पत्तौ सत्यां हर्षो भ
वति॥ तथा अनेन कार्येन सत्तां शीघ्रं विष्यति॥ किं च इ
तः परं तव भाग्यमपि हस्यते तेन वस्त्र वैभव्यानमानम्भ
विष्यति॥ ४८॥ हवह॥ भोः फक्कुक्व यत्तोकु आपि ग
मनं वा कुत्सित न मतैसाहि॥ सर्वपु अपारे यारा हि सिद्धि
भविष्यसि॥ धाश्चितत्वे सोपि हस्यते तेन लक्ष्मी प्राप्तः॥
इतः परं तव शुभादि वसा हस्यते ब्रह्मत्वात तव सर्व कार्य

श्री०

वि

विसिष्यांतिनात्रसंदेहः ॥५०॥ स्त्रस्य ॥ भो पक्षपते श्रूयतां
त्वयोक्तिं तु इप्सित प्रयोजनं प्रभो व कश्चित् एव सर्वे
पि जानाति तत्र यत्नमकुरु एतस्य योजनं तव शोभनं
भवति ॥ यदि सिध्यति महता यत्नेन देवयोगेन सि
ध्यति चेत्तदा बहुभिः सह विरोधो भविष्यति ॥ नान्य
पाश्रुतस्य तत्कार्यं यत्नेन परिहर्तव्यं ॥५१॥ दंष
ह ॥ भो पक्षपते श्रूयतां त्वया चिंतितं मे तन्मयोप्यनंद्रु
तौ चन्द्र तेरः ॥ तस्मात् पितं वपुरेवे नागः यतः टीति एतत्
कार्यं सिध्यति यस्मात् तद्वद्गुनसपि नीयाति ॥ ते
द्द दिवकार्ये रतः परं भद्रादि रसा ह स्पते ॥ तेनोक्तं सतो

२८

२८

यंकरिष्यति ॥ प्रश्न ॥ ५३ ॥ इदंच ॥ मोप्ळ छुवरूपतोतवपुरूयम
स्तितेन सत्वा त्वया चिंतित कार्यं सिध्यति त्वंभ द्रभ
विष्यति एतदर्थं सावधानं कुरु ॥ आसत्यंत्वं चैवि
चतवस रुस्तिवा रिचतस्यान्दयं मा कुरु ॥ ५३ ॥
इश्रद ॥ मोपळ छुवप्राति पद्य तां त्वया चिंति तं कार्यंसि
मुद्रम्पिचम हूनंपस्पतिदुःसाध्यमिदं कार्यंयद्य पि
मह तापस्यो इयेनसिध्यति ॥ तथापि सुवंनासि
ध्यति ॥ तत्वेदं मा कुरु पळुर्थं वृत्ततेतदेवसिध्यति
तापरं ॥ इत:परं तवभद्रं हस्पते ॥ ५५ ॥ इदंच ॥ मोप

श्री०

१८

छर्थ अर्थधारणां कुरु ॥ त्वं सर्वेषु स्थितो सि चिल
त्वं प्रभुत्व ॥ सिध्यति तत्वे कृते सा तिथा यत्नास्यति ॥ इय
मीयत्वं वा छलसि तस्य वैसिध्यति अतः परं यदि चित
योपरि वैचित्र्य अत्रो विलंबयतो चयातितेषां रखना
करतं मा कुरु ॥ किंच इतः परं तव सर्वोपि दिवसाः
सुभा हस्पतेते मत वसतो भंकरिष्यति ॥ ५५ ॥ इय
त्र ॥ भो पृच्छक त्वाहितं स्मत्त्वयाच्चिंतितं मतस्मिन
कार्ये सत्रवो बहवो विद्यंते ॥ ते च तव उपरि विरुद्धं चिं
तयति कुर्वंति च तेषामुपरि खेदं मा कुरु ॥ ते च मह
न प्रयोदया हस्पतेते न सर्वे सिध्यति निश्चितं ॥ ५६ ॥

१८

ह्याय ॥ मोपछकआवध्वरयतपाखाचीतितं सर्वं
तेहत्नेनसिध्यातिकिंतुचर्मचत्नेनसिध्यति ॥ अर्थी
रवविंचिंद्गमंकुरुतेन सर्वं सिध्याति ॥ इतः परंतवदि
वस्वास्त्रमाहूस्यांतेतेचुतवमनसितंतोधेधरिष्याति ॥
८७ ॥ दृढव ॥ मोपछ रू अ व गम्यतां लयपाचीतितं
भार्यंतदतीवविक्रमतरं केनापिधातुंमसक्यते ॥
यथ्यासिंहस्वस्तुवेहस्ततं छेपनं केनापिधर्तुंनसक्य
ते ॥ तद्दतेत्वाषंन सिध्यातिअन्येइंपाकुरू ॥ प
दिष्यसम्नेपि प्रहृतादैषयेपेनसिध्यतियेततांद्वैष
यतिधीमंजानातिअपितुधोमनजानाति ॥ ८५ ॥ द्व

श्री०

१८

मोपछन्नं अवध्यारनं कुरु त्वया चिंतितं कार्यं अ
नायसेनासिध्यति ॥ सिद्धे सातिकश्चित् दर्पिला
मोहस्यते इदं कार्यं चंद्रवते ॥ तं वसंतो थोया विष्ण
तिइतः परंतं वदिवसायेद्राहस्यं तेतैः ज्ञात्वा त्वं सक
लंपदं यानभाजनं भविष्यति ॥ ५८ ॥ टयया ॥ मोप
छन्नं अवध्यारनं कुरु त्वया चिंतितं एतस्मिन् का
र्ये अर्पिलामो अन्यायसेन हस्यते ॥ नष्टं द्रव्यम
पिलभति लघुप्रयोजनं मांहितं भवति ॥ पृष्ठापि सच्चेवे हवि
रुद्धं आलोचयंति तस्यापि वैर्यं ॥ ह महा मुनिव

१८

तइतःपरंहंवमागत्तइसा वृहस्पतेतया ज्ञात्वा सर्वंसिध्य
तिनात्रसंदेहः ॥ ६० ॥ इत्यर्थ ॥ भोपृछकत्वस्यरात्म
याचिंतितंस्तस्मिन्नकार्ये दीर्घकाले दीर्घकार्यं दी
र्घफलं वृहस्पतौ ॥ अनेनकार्येनमनं दोपिवृहस्पतेत्वं
संयोगेइष्टंभाविष्यति इतःपरंतवदिसिसत्रुयैविघ्र
तेतेपिशेषफलंभाविष्यति अतस्त्वयास्थिरंचित्तं
धृत्वसंतोषंकुरु तेतवसर्वंभद्रंभाविष्यति नासंसं
देहः ॥ ६१ ॥ इत्यर्थ ॥ भोपृछकस्थिरात्वयाचिं
तितंस्तेनमार्यंसंपवयपरापक्षेनोअपि नसिध्य

तितत्वापरतुंयन्तुमनितस्येयो भमहत्वंविंलजानारा
भ्रमुभोदयेनह सगातमापि दृष्यांस्थिरंनमवती ॥ त
त्रविधादंमगुशे तलडुपसांत्पेयं इच्छ देवतगएजाह
मदानादिकोर्यं भुत ॥ तेना पाचितमापि दृष्यांपि
नातिसर्वंसिनीठं वयवाती यहां ह्रसितरूदेवति ॥
इतः परंतवभाग्यफलं हस्तेनानसदेह ॥ ३१ ॥ स्वथा ॥
मोप्पछवस्यराघवमाचिंति तेभावे प्रपतिस्रा मोस्ति
मध्येवेवद्रुद्र मातितेष्वासवासाभ्ययमाशुता ॥
यथायोधीरे [illegible] सः मीहागम्नेसत्वामयंकरोति ॥

तहृदिदं कार्यं मतस्यचास्थिरचित्तोप्युवकुमतीं त्यजनु
मन्यते तर्हि दिवसा-सुमुमन धहस्पुते तैः ज्ञात्वा सर्वं भ
ध्याति ॥ तानि यदि नानि लक्षसंतोषं यो सुस्पादयंति ॥
॥ दृष्टा दंपत्याः ॥ भोपवचन आवर्तीय त्वया चिंतिते
भार्येतिरस्मिन्स न योवह वोरि ध तोतेषां स्वकांकिंमा
स्याः त्वं नजानासि ॥ भोधम ध्येकेचन कुद्रा सं
तिष्ठ धधन्नवृ स्पत रहात्वा स्थिरत्वं तौ भवेन्मा तिं
त्यज संतोषं कुरु ॥ तेन तथ भार्येसि ध्याति ॥ पुनं
तवभूरतमार्तिषं जातो ॥ कुद्रै भः सव सा चमा यि

श्री०

२१

गआसि परं ॥ पापप्रभीत्वाविग्गमाणि नभवे म परं भुव
णापिगमनंधंमंछिसि तण्णा न सतीविं बिंदि छवि
विदमीछं हस्य ते ॥ तऊ पसात्यवीमिछ देवतापज
हो माहिं अंऊत ॥ तंसवं हुंहो पयु यंतै वरयाति ॥
तवमनं सिमहा तं संतो बं परिष्पाति ॥ प हांहु
सितंतंसवं सोध्वयाति ॥ तविष्णासी आवसंदे
हं ॥ ६४ ॥ इति द्समपरमं ॥ तम्मा प्रम

२१

(20)

तिथिवारं चनक्षत्रं नामाक्षरसमन्वितम् ॥ द्विगुणि चतु
र्गुणि गुणितं सप्ताढ्यं ८ रहू समाहरेत् ॥१॥ आदि
शून्ये भवद्धानि मध्ये शून्ये रिपोर्भयम् ॥ अन्त्य
शून्ये भवेन्मृत्युः सर्वो की विजयी भवेत् ॥ २ [illegible]
दो चन्द्रमासे यो मेषा है लग्नमेव च ॥ तिथि भेसमा
योगे भरामे नापिहरेद् बुधः ॥ ३ ॥ शून्ये मृत्युर्द्वयो हा
नि रैका जी विजयी भवेत् ॥ ४ ॥

(21)

श्री० ॥ दिनरात्रिजनोपयोगा शुभादिवेला दि० म्रा०

चौघरीआ

रवि		चन्द्र		भौम		बुध		गु		शुक्र		शनि	
दिन	रात्रि	दिन	रात्रि	दिन	रात्रि	दिन	रात्रि	दिन	रात्रि	दिन	रात्रि	दिन	रात्रि
उद्वेग	शुभ	शुभ	चर	रोग	काल	लाभ	उद्वेग	शुभ	अमृत	चर	रोग	काल	लाभ
चर	अमृत	अमृत	रोग	उद्वेग	लाभ	अमृत	शुभ	रोग	चर	लाभ	काल	शुभ	उद्वेग
लाभ	चर	चर	काल	लाभ	उद्वेग	काल	अमृत	चर	रोग	अमृत	लाभ	रोग	शुभ
अमृत	रोग	रोग	लाभ	अमृत	शुभ	शुभ	चर	लाभ	काल	काल	उद्वेग	उद्वेग	काल
लाभ	काल	काल	अमृत	काल	अमृत	रोग	रोग	अमृत	लाभ	शुभ	शुभ	चर	रोग
शुभ	लाभ	चल	काल	शुभ	चर	उद्वेग	काल	काल	उद्वेग	रोग	अमृत	लाभ	काल
रोग	उद्वेग	उद्वेग	शुभ	उद्वेग	रोग	काल	लाभ	उद्वेग	शुभ	उद्वेग	चर	अमृत	चर
उद्वेग	शुभ	शुभ	उद्वेग	रोग	काल	लाभ	उद्वेग	शुभ	अमृत	चर	रोग	काल	शुभ

22

श्रीगणेशायनमः ॥ त्रिपुरस्यमुहूर्तकेन दृष्टं शुभं च सर्व
तमपि किं दृष्टं शुभं नास्ति हेतौ ॥ यद्विशुभमशुभं वा
वाह्यं वर्तते ह्यपि वस्तु दैत्यैः सर्वदा चिन्तनीयम् ॥
॥१॥ शिवालिखितमित्येतत्शाधैर्यास्युभभाषितम् ॥
तस्य संस्पर्शो न देव जायते वस्तु भस्म भस्म ॥४॥ नाति
पिर्नैव न दृष्टं नैमेण: भस्यानच ॥ स्वरूपेन योगी तीरा
सिन्धिरा नतमेण्डसाः ॥२॥ व्यतीपाते चु संक्रांतौ भ
द्राया मस्यु मे दिनै ॥ शिवालिखितमास्ये भस्य सर्वावि

मृतानां प्रवेसं च वकासें च नस्य छुति ॥ तत्स हृस्तमिदं का
र्यफलं मनः सुभासुभफलं भावस्य स्पर्धार्यमरस्य ते भ्राते
लत्वा र्वत्वारितं नसिध्यति एतदेवाधहा साध्यमेतत्वा
र्यप्रारिस्यन्यमन्यत्वा र्य चिंतयत्वरितं सिध्यति नार्थस
देहः ॥ ३२ ॥ ववय ॥ ओष्ठ छुव व्रध ध्वारय ॥ पण्यास्य
तिनि रूपया स्यहं ॥ त्वया चिंतितये तस्मिन् कार्यसिद्धि
रस्ति सतो वापि महा र हस्य तेसां प्रतंतव कश्चित्तस्मुभे
दयो हृस्य तेन वचुद्धिमान्भुत्वा यत्किं चिन्मनसि चिंतय
सितत्का र्यसिध्यस्ये व कालो मुंच दीततां त्वन्ना महत्प्रा
स्य सित्वया चिंतितं का र्यं दैवादिना बाधितुं न सात्वेति

श्री०

२२

इतःपरं तव पुनः सहायो ऽस्ति तेन यत्र यत्र स्वयमेव मनसि चिंतय
सि तत्सर्वं सिध्यत्येव नात्र संदेहः ॥३२॥ इति वप्रकरणं ॥ य
यय ॥ भो पृच्छक त्वया यत्कार्यं चिंतितं कार्यं सुखेन सिध्यति
त्वयि घ देवता भक्तिं कुरु ॥ यथा कलादीनि चंद्रः क्रमे
ण संपूर्णो भवति तद्वत्तवापि संप्राप्तिः क्रमेण भविष्यति ॥
अन्यच्च तव ये चान्ये वैरिणः ते तानपि निर्जित्य त्वदीयं
कार्यं सिध्यति नात्र संदेहः ॥३३॥ यय२ ॥ भो पृच्छक भव
धारय स्वचिंतितं कार्यं न सिध्यति हस्तायातं कार्यं नाशयिष्य
ति वैरियं दैवी याति सा च स्वेच्छया भवति तत्र भेदं मा कु

२२

रूत्वस्वकीयेष्टदेवतांपूजदप्रजितेसतिराजभयंनाना
प्रकारवक्षुद्रोपसर्गातिभीर्विष्यतिस्वर्वांछितंकार्यंभवत्येव
नात्रसंदेहः ॥ ३४ ॥ यरद ॥ भोपृच्छकयंत्वयामनसिचिंति
तंतदेवतागम्यतांत्वयाचिंतितेकार्येसत्रयोवहवेपनिवेप
काःसंतितेचसत्रवःपरोक्षेत्वोपरिविरूद्धंवदंति ॥ चिंत
यतिचूतवायेवाकुभावचनंकुर्वंतितेषांविस्वासंमाकुरु ॥
दीर्घकालेनानायत्नेनतवकार्यंसिध्यति ॥ इतःपरंतव
कुशमपिहृस्यंतेतेनभद्रंभविष्यातिनात्रसंदेहः ॥ ३५ ॥
मयव ॥ भोपृच्छकत्वयासुभासुभंचिंतितंतदपेचारयस्व

श्री०

१३

ते

याचिंतितंमेतत्कार्यंसुसाध्यंतथापिइच्छेद्यतापनोकुरु

त्वयाचनहत्वातवसंसारेपद्मताभाविष्यतितंचसर्वोपका

रीभविष्यवैचनतवसत्त्ववार्त्तिष्यंतेयभद्रंकारिष्यंतिकिंच

तवभाग्यफलमस्तित्वंमनसिविषादंत्यजेतत्सकास्मात्स

र्वंसिद्धिर्भविष्यति॥३६॥यथद॥भोपृच्छकस्त्वयतात्वया

चिंतितंएतत्कार्यमतीवगहनंदृश्यतेप्रत्यदेनमसन्नो

दृश्यतेपृष्ठतोपकारस्वरूपंदृश्यते॥अतएवत्वयितंनसि

ध्यतियदिसिध्यतितदैवदेवतावतेनदीर्घकालेनच

सिध्यति अतएवएतत्कार्यंपरित्यज्यअन्यथावंचिंतय

तत्त्वरितंसिध्यति॥३७॥यदव॥भोपृच्छकचिंतितमर्थ्या

१३

रयाचिंतितंत्वयाप्राप्स्यसिध्रुवंतेपत्वंइष्टदेवताप्रसांकु
रुतंयाचेदत्वासर्वसिद्धिर्भविष्यतिपूर्वदिधसावित्र
मतंप्राप्ताइदानींसुभोहस्पतेनात्रसंदेहः॥२८॥यदय॥
भोपृछकसायथायेनत्वंस्फुराुयत्वयाचिंतितंएतेत्का
र्यंसिध्यतिनोवाइतिमहत्संदेहस्तवमनसिविद्यतेम
ग्रानुगस्यचहस्पतेएतत्कार्यसंत्रुवकुलंजातस्वभ्रहंत
हस्पतेतदुयसांत्वर्ष्यंपपिचाहिष्टदेवताप्रसांकुरुत
याचदत्वासर्ववांछितंतत्रसंदेहः॥२९॥सप्रसाद॥भो
पृछकसमनोभिलाषंस्फुराुत्वमभ्यत्रसमस्तांकुरुस्वीयद

(28)

श्री०

२४

सत्वासर्ववांछितं येध्याति स्वगुरुधर्मान् विंछितं चिंतो
नवैतेन सर्वसिध्यातिकिंच त्वदीयस्पात्रेषु चिंतुसतत्त्वस्या
नवार्तासप्रमामि ध्यायाति ॥ ४० ॥ यवव ॥ भोपछ कपस्पछ
सितत्वं सत्पुत्रं कार्यमेवांचितं यस्मिंतस्पकार्यं सपके व
नप्रतियेध्वकासते अतः भारराराइतत्कार्यं त्वरितं नासि
ध्याति यदि चेत्सो ध्याति तदा महतो वाछे न तदा वजेन
विरोध्वैध्यवि ध्याति ॥ ४१ ॥ यश्रव ॥ भोपछ कपुष्यतां
त्वयारीति ते स्तास्पिनकार्यं कर्वीन हास्पतो ॥ सन्नुवलता
सरकार्यं भद्रं न भयाति भूमेन कार्यं जयरत्नौ कानासि

२५

ऋतौ रोगविरोधश्च बृहस्पते॥ तत्र संतोषं प्रकुरु तदुप

शांत्यर्थं स्वेष्टदेवतापूजा होमदाना दिकं कुरु॥ तेनस्व

यमेव नाशमेस्यति॥ सर्वं सिध्यति नात्र संदेहः॥ ५२॥

यप्रश्न॥ भो पृच्छक त्वं स्वेष्टं त्वमर्पितं मंचिंत

यसि सो पवस्या लक्ष्मी लभ्यते पूर्वमितः परं कुका

तं च कार्यं नैव सहसा हि वंशा परं तु न सिध्यति इदं भी

न वह स्तौ नापा से न श्रा गाम्य सि ध्यति कार्य गमनं न धारन्न

सि त्व विष्टदेवता पूजा दिकं कुरु दानं च तेन मनो गतं

श्री॰

१५

कार्यंसिध्यति ॥ ४३ ॥ यदस्य ॥ मो॰ प्ध्यस्तु पतांत्वया।
चिंतितं कार्यमेतद तीवाद्भुतं भयदा पर्कं समहता वछन
सिध्यति यथा दुर्गसिध्यो ॥ यथापुरुषः सुखेन तिष्ठति त
वापिमनो चिंतितं तदमनं कोचे त्पुरुषाः प्रातिबेध्य वं
ति तेषो वृष्यतंमा स्पृशां किंचात्रि छ सिध्यार्थपकरनमति
॥ स्वेष्ठ देव प्रजभं श्रुत्वा तेन सर्वमादेशं सिध्यति ॥ ४४ ॥
यमुधा ॥ मोच्छव स्पृश्यु यावि चिंतितमेतत्कार्यं तैस्त
गीतिसमाधानं वाच तैर्भेमास्ति लाव हर्तिका स्वल्पतिमानंय
त्वा तो हत्वा यमिदं तत्त्वा कुरुष्व पः किंचिद्धितीयते वेदन

१५

प्नातिविरुद्धं चिंतयंति स्वल्पं तिष्टदं गवत ।। प पाष्टदं
गस्य पिंडे दत्तो साति प्राति सुभगो ष्वनिर्मैवाति नस्य पा
तद्धत्वा यमिदं किं चितत्र दे पसांत पर्यविंचित ।। इष्ठदेव
ता पूजा धन हेम्नाविद्धा भोदिकं त्रियते तेन ताता अयं
त्वै कार्यं सिध्यति ।। ४५ ।। पञ्च प ।। भो पृछ यत्वयाचिं
तितं कार्यमेतौ वस्तुनं महांतं कष्टं विना न सिध्याति धुवं
साध्यमिदं ।। अयं स्वतके परिदुष्ट जना वा संधरा वे
दं वदंति कुर्वंति तेषां वचनं त्वं किंदयेन धारयासि ।।
तदुपरि पश्च इष्ठ देवता पूजा होम दानविधानादि धु
वं तेनैव भीष्ठं कार्यं सिध्याति ।। ४६ ।। पपअ ।। भो

32

श्री०

२६

पच्छकस्यप्रु त्वयाचिंतितं कार्यं सौभेन हृक्कं दसेोनढं
सीतैव्यावतु ॥ किंचितसीतंकिंचि दुख्याअतएव
कष्ठसाध्यौतसुखसाध्योपायोस्ति ॥ त्वइच्छदेवता
पूजाहोमदानादिविधानंकुरु तेन तत्कार्यमपि
प्रयासेनभविष्यति ॥ सुखेनस्वमतेसिद्धकार्यंभवि
तिनात्रसंदेहः ॥ ४७ ॥ यआआ ॥ भोपृच्छकस्प्रगुत्वया
चिंतितंपार्यमार्गेवगाहनंआवास्यउत्तमप्राप्तं आसा
ध्यं ॥ यदिवस्तुप्राप्तिसाध्यंभवतितदा धर्मसाध्यंना
म प्राप्तदर्शसिद्धदेवतापूजाहोमदानादिविधानादिकं
कुरु तेन धर्मवतेनातवेष्ठकार्यसिद्ध्यातिनात्रसंदेहः ॥

२६

कुष्वदिने मुहूर्त

रु	आ	रा	वा	वि	नं	य	सौ	ध	सा	रा	श्वि	मै	चा	ज	वे	
त	त	स	स	र	र	त	त	स	स	र	र	त	त	स	स	
ठ	ठ	४	४	५	५	५	५	५	५	ठठ		५	५	५	५	मा॰वदि
४	ठ	४४	४४	४	४	४	४४	४४	४		४	४	४	४	५	जे॰ष्ठादि
ठ	४	४	४	४	५	५	४	४	४	४	४४	४४	ठ	४	४	कु॰ग्रमादि

मा॰ फा॰ चै॰ वै॰ श्रा॰ भा॰ ज्येष्ठ॰ आषाढ॰ कु॰ का॰ मार्ग॰ पौष॰

१७ धुंधरत्नौ मुहूर्त

श्रा	रा	बा	वि	नं	य	सो	भ	सा	रो	श्वे	मै	चा	ज	वे	तु	
र	र	त	त	स	स	र	र	त	त	स	स	र	र	त	त	
८	८	८	८	८	०	६	६	८	८	८	८	८	८	६	६	माघादि
८	६	६	८	८	०	८	६	६	८	८	८	०	०	८	८	ज्येष्ठादि
५	५	५	८	०	५	५	८	८	८	६	६	६	६	०	८	कुमारादि

मा०फा०चै०वै०श्रा०भा०ज्येष्ठ०आषा०ढ०कु०का०मार्ग०पौष०

[illegible]वदिमे
[illegible]दिमे मुहूर्त

रा	वा	ति	नं	य	सौ	भा	सा	रो	श्वे	मे	चा	आ	वे	तु	श्र	
स	स	र	र	त	त	स	स	र	र	त	त	स	स	र	र	
४	४	४	४	४	४	वि	४	०	४	४	४	४	४	४	४	माघादि
४	४	४	०	४	४	०	४	४	४	०	३	६	४	४	४	ज्येष्ठादि
४	४	४	४	०	०	४	४	४	४	४	४	४	०	४	४	कुंवारादि

मा० फा० चै० वै० श्रा० भा० ज्येष्ठ० आषाढ० कुं० का० मार्ग० पौष०

(36)

बुधदिने मुहूर्त

तु	अ	रा	वा	वि	नं	य	सौ	प्र	सा	रा	श्वि	मे	चा	ग	वै	
त	त	स	स	र	र	त	त	स	स	र	र	त	त	स	स	
४	४	४	४	५	५	५	५	५	५	४४		५	५	५	५	मासादि
४	४	४	४	४	४	४	४	४	४	४	४	४	४	४	५	गोछादि
४	४	४	४	४	५	५	४	४	४	४	४	४	४	४	४	कुम्भादि

मा० फा० चै० वै० श्रा० भा० ज्येष्ठ० आषाढ० कु० का० मार्ग० पौष०

37

धुधरत्री मुहूर्त

रु	रा	बा	वि	नं	य	सौ	भ	सा	रो	श्वे	मै	चा	ज	वै	तु	
र	र	त	त	स	स	र	र	त	त	स	स	र	र	त	त	
८	८	८	८	८	०	८	८	८	८	८	८	८	८	८	८	माघादि
८	८	८	८	८	०	८	८	८	८	८	८	०	०	८	८	ज्येष्ठादि
७	७	७	८	०	७	७	८	८	८	८	८	८	८	०	८	कुंभादि

मा० फा० चै० वै० श्रा० भा० ज्येष्ठ० आषा० ढ० कु० का० मार्ग० पौष०

श्रीवृद्धिमे
ग्रहदिने मुहूर्त

रा	वा	वि	नं	य	सौ	मा	सा	रौ	श्वो	मै	चा	त्र	वै	तु	भ्र	
स	स	र	र	त	त	स	स	र	र	त	त	स	स	र	र	
४	४	४	४	४	३	२	३	०	४	४	३	३	३	३	३	माघादि
४	४	३	०	३	३	०	४	४	४	०	५	६	४	४	४	ज्येष्ठादि
४	४	३	३	०	०	४	४	४	४	३	३	३	०	४	४	कुआरादि

मा० फा० चै० वै० श्रा० भा० ज्येष्ठ० आषाढ० कु० का० मार्ग० पौष०

८

यत्रायां मुहूर्त

बा	बि	ने	य	सौ	म	सा	शै	श्वे	मै	चा	ज	वै	नु	आ	रा	
त	त	स	स	र	र	त	त	स	स	र	र	त	त	स	स	
५	४	४	४	५	५	५	५	०	४	४	४	४	४	४	४	
०	४	४	४	४	०	४	४	४	४	४	४	४	४	४	४	माघादि
५	४	४	४	०	४	४	५	५	५	४	४	४	४	४	४	ज्येष्ठादि
												४	४	४	४	कुआरादि

मा० फा० वै० वै० श्रा० भा० ज्येष्ठ० माघा० कुआ० मार्ग० पौष०

शुभदिने

वि	नं	य	सौ	भ	सा	शै	खे	मै	च	ज	वे	तु	भ्र	ता	वा	
र	र	त	त	स	स	र	र	त	त	स	स	र	र	त	स	
२	२	४	४	०	१	१	१	१	१	२	२	१	२	१	०	माघादि
२	२	१	१	१	१	१	२	१	१	१	२	२	२	१	१	ज्येष्ठादि
१	१	२	१	१	१	१	१	१	१	२	१	१	१	०	४	कुम्भादि

मा० फा० चै० वै० श्र० श्रा० भा० ज्येष्ठ० आषाढ० कु० का० मा० पौष०

८ स्फुरसोत्रौ

मुहूर्त

मं	य	सो	भ	सा	रो	स्व	मै	चा	ज	वै	तु	आ	रा	वा	वि	
स	स	र	र	त	त	स	स	र	र	त	त	स	स	त	त	
५	५	८	८	४	०	८	८	५	५	४	४	४	०	५	५	माघादि
८	८	४	४	४	४	८	८	०	४	४	४	०	५	५	४	ज्येष्ठादि
८	८	८	८	८	८	८	८	८	४	४	४	४	०	५	५	कुम्भादि

मा०फा०चै०वै०श्रा०भा०ज्येष्ठ०आषाढ०कु०का०मार्गा०पौष०

रात्रीदिने

मुहूर्त

प	से	अ	सा	रो	श्वे	मै	चा	ग	वै	उ	अ	रा	का	वि	ने	
त	त	स	स	र	र	त	त	स	स	र	र	त	त	र	र	
५	४	०	०	०	४	४	४	४	०	४	४	०	४	४	०	माघादि
४	४	४	४	०	४	४	०	४	४	०	५	५	०	४	४	ज्येष्ठादि
५	४	०	०	०	४	४	०	४	५	५	४	०	४	४	५	कुआरादि

मा० फा० चै० वै० श्र भा० ज्येष्ठ० आषाढ० कुआ० का० मार्ग० पौष०

शनिराशौ मुहूर्त

१०

सौ	म	सा	रो	स्व	मै	वा	ग	वै	तु	श्रा	रा	वा	वि	नं	य	
र	र	त	त	स	स	र	र	त	त	स	स	र	र	त	त	
[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	माघादि
[illegible]	[illegible]	[illegible]	[illegible]	०	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	ज्येष्ठादि
[illegible]	०	[illegible]	[illegible]	[illegible]	[illegible]	०	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	[illegible]	०	०	[illegible]	कुआरादि

मा० फा० चै० वै० श्रा० आ० ज्येष्ठ० आषाढ० कु० का० मार्ग० पौष०

ज्योतिष

अथ राहुविचारः ॥ अलौवृश्चभौ नक्रे च पूर्वतो राहुसंस्थितिः ॥
मीने च मेषे चैव दक्षिणे नित्यसो लभः ॥ वृषे च मिथुने कर्के
पश्चिमायां वतिष्ठति ॥ सिंहे च कन्यायां घटे पोरुत्तरे स्थवि
धुंतुदः ॥ राहुपूर्वां दिशामारभ्य तत्राग्नि कोणवायव्ये स्थितः
मतो दिशा ॥ वर्तनेऽष्टः सन्मुख वा मतः ॥ मा पस्कृ वि
चारः ॥ तर्का द्विने त्र दिक्पूर्व शस्त कं ॥ न लोल रंवा मुनि
दिशा त्रि ॥ नागाग युग्मे दिशि पश्चिमायां याम्ये च दिग्व
दशाचि प्रशस्तः ॥ शान्मुरवे अर्थनाशाय भक्तनाशाय

१८

प्रा ८:

अथ विवाह कन्यागतं: मृगसिका बज्जितम ॥ विवा
हम भे पादि कन्यका गतं दानदो रखो व्यव शुक
संभव: ॥ उतर्गपुत्मारसिकराज्ञविंति तं वदन्ति म०
२ वादि महा मुक्ती १ आप गावाङ्ग मंत्र: ॥ अर्जु
न: फाल्गुसो जी हीमः किरी टी श्वेत वाहन: विधम
र्जीजय: कृष्ण: सव्यसा चीध्नंजय: १

५८

[OrderDescription]
,CREATED=16.10.20 14:47
,TRANSFERRED=2020/10/16 at 14:53:20
,PAGES=56
,TYPE=STD
,NAME=S0004055
,Book Name=M-954-PASHAKTALI
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF
,FILE19=00000019.TIF

FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF
,FILE34=00000034.TIF
,FILE35=00000035.TIF
,FILE36=00000036.TIF
,FILE37=00000037.TIF
,FILE38=00000038.TIF
,FILE39=00000039.TIF
,FILE40=00000040.TIF
,FILE41=00000041.TIF
,FILE42=00000042.TIF
,FILE43=00000043.TIF
,FILE44=00000044.TIF
,FILE45=00000045.TIF
,FILE46=00000046.TIF
,FILE47=00000047.TIF

FILE48=00000048.TIF
,FILE49=00000049.TIF
,FILE50=00000050.TIF
,FILE51=00000051.TIF
,FILE52=00000052.TIF
,FILE53=00000053.TIF
,FILE54=00000054.TIF
,FILE55=00000055.TIF
,FILE56=00000056.TIF
,